ASHA ARCHIVES
3212

ॐ

वज्रक

१२ श्री [illegible] रणी वज्रोदेवीस्तोत्र

ॐ नमो वृन्दी देव्यै:॥ ॥नमो वन्धमो
अरीदेव्यै:॥ ॥नम:स्वामिमहाविद्यां
राजवन्धनमोक्षकां॥सर्वशान्तिकरीचै
वसर्वपापप्रणासिनी॥ १ ॥संजितां
जयदात्रीश्चग्रहपीडानिवारिणी॥देवदा
नवगन्धर्वसिद्धिचारनुपूजितां॥ २ ॥

सकलानुग्रहकरीयक्षराक्षससेवितां
कुंकुमांरक्तवर्णां रक्तांवरधरांसुभां॥ ३
बाहुयुग्मांविशालाक्षिं वन्दीदेवीं नमा
म्यहं॥जननीसर्वभूतानांराज्ञाश्चैव वि
शेषत:॥ ४ ॥सर्वसिद्धांसुसिद्धां च
सर्वमायी तथा॥सर्वविद्याप्रदात्री

श्चसर्वाभयंजयप्रदं॥ ५ ॥वन्दीदेवी
प्रसादान्‌जयोभवतुसर्वदा॥वध्यमो
क्षमवाप्नोतिसुरासुरगणार्चितः॥ ६ ॥
अतस्त्वमनुष्येसुयसेदेवीनेनमः॥
यः इदंप्रयतोभूत्वावाधांस्तोत्रमनुत्तमं
॥ ७ ॥प्रत्यहंपठतेभक्त्यावध्यनान्मु

च्यतेचिरात्‌॥अस्मिंचैवराजानेवसं
कुर्यान्नसंसयः॥ ८ ॥विजयंलभते
नित्यंनगच्छेत्परजयं॥श्रियंचपरमा
प्नोतिसौख्यंमोक्षंप्रजायते॥ ९ ॥प्रति
दिनमिदमेवंस्तोत्रराजंचदेव्याः सक
लगुणगणाढ्यंवन्धुवृद्धिंकरोति॥ भ

वतिविपदसंस्थावन्धनान्मुक्तदेहः पठ
तियदि मुनीन्द्रः सर्वविद्याधरेन्द्रः ॥१०
स्मरतः पठतो वापि वन्धनस्थापि दूर
तः ॥ पीडाशान्तिर्भवेत्तस्य ग्रहराजकृता
तथा ॥ ११ ॥ लिखित्वा भूर्जपत्रे च धा
रयेद्दक्षिणे करे ॥ श्लोकमात्रस्य पाठेन

वन्धं तं यान्ति नाशनं ॥ १२ ॥ विमुक्तः
सर्वदुःखैस्तु पूज्यते राजवल्लभैः ॥ १३
इति श्रीभूतडामरतन्त्रे शिवगौरि सं
वादे वन्धमोक्षणी वन्दीदेवी स्तोत्रं स
माप्तम् ॥ शुभम् ॥ ॥ ॥

श्रीसंकटायैनमः॥ ॥अस्यश्री
संकटवन्दीमोचनस्तोत्रमन्त्रस्यइन्द्र
ऋषिरनुष्टुप्छन्दः श्रीवन्दीमोचन
देवताममयुक्तफलसिध्यर्थेवन्दीमो
चनस्तोत्रजपेविनियोगः॥ ॥
वन्दीदेविनमस्तुभ्यंवरभयवशोभ

ने॥ ह्रांह्रींशरणांगतः श्रीप्रमोक्षंददस्व
मे॥ १ ॥वन्दीकमलपत्राक्षिलोहसं
कटभंजनी॥ प्रसादंकुरुमेदेवीशीघ्रं
॥ २ ॥त्वंवन्दीत्वंमहामायात्वंदुर्गा
त्वंसरस्वती॥ त्वंदेवीराजनश्चैवशीघ्रं
॥ ३ ॥संसारतारणीवन्दीसर्वका

3212
ASHA ARCHIVES

मप्रदायनी॥ वाक्कल्मषक्षयकरी॰
शीघ्रं॰॥ ४ ॥त्वमेवश्रीईश्वरीचत्वं
ब्रह्माणीब्रह्मवादिनी॥त्वच्छक्तिप
राशक्तिशीघ्रं॥ ५ ॥नमस्तुभ्यंम
हालक्ष्मीइन्दुकुण्डलशोभिते॥वि
शालरक्ताङ्गवाशीच॰शीघ्रं॰॥ ६ ॥

नमस्तुभ्यंमहादुर्गेमहादुःखारतना
शिनि॥महादुःखप्रशान्ति॰शीघ्रं॥ ७॥
इदंस्तोत्रंविरचितंयःपठतेनित्यमे
वहि॥सर्वपापविनिर्मुक्तं॰शीघ्रंमोक्ष
मवाप्नुयात्॥ ८ ॥इतिश्रीविन्दी
मोचनस्तोत्रमसमाप्तंशुभमात्॥ ॥